महोग्रहेरुक

ॐ नमः श्रीमहोग्रहेरुकाय॥ ॥तथतासिद्धिवाचानित्यपूजाविधिमाह॥ ॥समं
तमद्रप्रज्ञोपायमहोग्रहेरुकवाह्याभ्यन्तरं गृह्य तनथैवचक्रेश्वरश्रीवीराधिपादिनवमंभा
वयेत्॥ वाचाष्टानांविधिः॥ जिनेन्द्रक्षांनक्रोधायनमः॥ तथागतसाधकाष्टवाचानेषांजा
पसाधनयोगध्यानकरणार्थं॥ आदौरक्षाचक्रं द्वितीयपंचधातुक्रमेणमण्डलंनिर्म्माय
तृतीयदेवताध्यायेत्॥ चतुर्थआकर्षयित्वामण्डलंस्थापयेत्॥ पंचमंपूजावंदनांकृत्वा
तवषष्ठमवाह्याभ्यंतरस्थानंचिंतयेत्॥ सप्तमक्रोधमन्त्रसमाधिकरणं॥ अष्टमध्यायधाकाः
मनासुप्रार्थयेत्॥ ॥प्रथ[illegible]रक्षाचक्रं॥ वा[illegible]॥ हूं कारादानिष्क्रान्तजिनेन्द्रमण्डलेन
त्रभाजनाभ्यंतरवस्तुदर्शनश्रवणादिसर्वशून्यताज्ञानेभ्यःचण्डदुष्टविघ्नद्वेषसर्वसुद्वे
वमूनद्विननिर्म्मितंस्थानजं॥ हूं एवंनत्रयाविरोधयित्वास्वकर्म्मविपाकात् सचचक्रडुर्गः
नसर्व
निःसत्वप्राणजानाभूवन्॥ ननिर्म्मितंश्रमाव॥ अफटिति हूं कारास्तु लं॥ चित्त हूं काररश्मिपरि
मितानासयित्वासत्त्वश्रक्षरकायज्वालास्फुरितविघ्नपिशाचादिभस्मयित्वारक्षाचक्रो
ज्वंगवाह्याभ्यंतरशून्यतायामहाक्रोधवाय्वजनिना ॐ हूं आः ठ जः ठ फट्॥ ॐ वज्रक्रोधस

वसमयः ॐ रुरु रुरु स्तोहं ॥ हुंकारेण सर्वक्रोधदेवेभ्यो नमः ॥ कौतुहलेवसनालैः नात्व
यित्वा वाह्याभ्यंतरगृह्यानेदम्रजयामि ॥ आत्मानं प्राणसंशं यो पिन विवर्जयितव्यं ॥ व
ज्रसमय अनिग्रहोप्रतिजहोः यमिनमो ॥ हुं अन्यत्सर्वक्रोधदेवता निर्विकल्पं भावयेत् ॥
समयहरदोषपापेन पतितानां दुःखवाध्यविनाशिनं ॥ समंतभद्रेलीन चित्वास्फुरि
त्वा महामण्डलं ॥ ॥ ॐ स्वभावशुद्धाः सर्वधर्माः स्वभावशुद्धोहं ॥ ॥ हुं सर्वस्फुरि
त्वा एकै सूतं धातुभष्मि महावाध्योद्भव निर्मल हुं कारात्मनि हृदि हुं तस्मात् यं रं सुं कं वं ॥ रे

णाकाशांतदुपरि वायुः तदुपरि अपः तदुपरि पृथ्वी तत्परि हाडाद्विपरिज्वलत् सकेन्द्र
त्रमण्डप्राकारं अनिर्मितस्वयं गुरास्मिनामण्डलं दिग्विदिक्समीपमध्यविनायितं तंनशक्य
अचिंत्यप्रासादं ॥ भ्रूं विश्वादिशुद्ध भ्रूं ॥ हुं आत्मनि हृदि हुं कार रश्मिस्फुरित्वा परिनिवर्त्य
पुनरश्मिनापूजादेवीभिः स्फुरित्वा पूजितं ॥ ततः गतिगतानां सत्वानां कार्यप्रसिद्धं विं
तयेत् ॥ ततः अलंभवस्वयं प्रकाशितं श्रीमान् महाहेरुक महाकाय कपालरत्नमिश्रितवर्णे
महातेजानलवज्रोज्वलितरविंशानिवक्रं अतिक्रूरमुखभयंकर रसवर्णलोलजिह्वाभि

नीलशुक्लरक्तदंष्ट्राकरालोर्द्ध्वोपरि दशदशनाड्यक्रोधोज्ज्ववंमध्योमध्य दशदंनाड्यश
क्रोधेश्वरीहाःकारश्वासविषधूमधूमयोनीवमहाग्निमकूरवंद्रसूर्य्याग्निनयनाभ्रूवौः
विद्युज्ज्वालाग्रहनक्षत्रादिसमुद्भवाः शिरोर्द्ध्वकेशारक्तपीनमिश्रितोर्द्ध्वज्वालाज्वलननाः
शाविवरान्तकालानिलनिर्गत्यनिर्म्माणवज्रुलंवक्रक्रमसुप्रोज्वलितेन हूंहूंर नादौगीर्णानं
पुनर्मुखान्तप्रादकोज्ववयडडायमानमहाक्षोभोग्निनवाष्पगर्भितं कर्णाज्जूमोज्ज्ववजा
मूलांधकारत्रिसाहस्रसंछादितं ततःमहामायासमन्नसद्वाकरयज्ञामालिंगिनासमंत

नर्द्धं॥ ॥हूंकारमण्डलद्यावन्त्वारिंशान्तुजिनसप्तादशासज्ञनिमुनिन्नयंदक्षिणाभुः
जाधरं जिनेश्वरीसप्तादशाद्दुर्गनिमुनिन्नयंवामभुजाधरं अष्टौपादाप्रत्यालीढपदाक्रा
न्तापराशवोष्टौ॥ वामकुंचितमहावलीज्वालान्नेरुप्टिनितद्धंदिनवभुखंमष्टादशभुजाक
ह्मरक्तमिश्रितवर्णेततःअष्टौपादावाद्धाक्रांतंदक्षिणभुजेखड्गागखलुयवनवज्रक्करन्त
यपरखड्गपरशुपाशं वामेसरक्तकेशकपालंतस्मूलिकाकपालंवन्द्रसूर्य्यमेरुरक्तसरोवर
वंह्निवायुःमूलक्रोधप्रज्ञालिंगिनाःतस्यहृदिविभुखंघटभुजंनीलसुक्लरक्तमुखंदक्षिण

भुजेषु वज्रं वामेषु कपालं चतुपादाप्रत्यालीढपदा । स्वाकाशधातुवर्ण्णु महाप्रज्ञालिंगिना
। पुनरनन्यहृत्मुसमाधिसत्वहेरुक रक्त कृष्ण मिश्रिनवर्ण्णु एकमुखं द्विभुज द्विपद प्रत्याली
ढपदा दक्षिणे वज्रं वामभुजे कपालं इषद्दंष्ट्रिनवदनं ऊर्द्धिनि समाधिः चित्तदेश ज्वलन्ति
नदृष्टि । हूं कार ज्वलन्मायेनील त्रिकोणमध्ये चित्तदेवपरमवज्रहेरुक त्रिमुखं मूलं नीलं शुक्ल
रक्त षड्भुज दहिने वज्र खट्वांग खलुपवनवः ॥ वामे सरक्त केश कपालं घण्टानंत्री पाश । प्रज्ञा
लिंगिनं ॥ हूं दक्षिणपार्श्वे पीतनील मिश्रिनवर्ण्णु त्रिकोणमण्डलोपरि मञ्जुश्री क्रोधयमान्त

कपीतनील मिश्रिनवर्ण्णु त्रिमुखं ष्वेत रक्त षड्भुजं । दहिने गडा खड्ग परशु वामे सरक्त के
श कपाल तर्जनी वङ्कलिका धरं । महामाया वेताली स्वालिंगिना ॥ ॥ हूं पश्चिमे रक्तनी
ल मिश्रिन त्रिकोणमण्डले पद्मवाक्काय हयग्रीव रक्त नीलवर्ण्णु दहिने शुक्ल नील वामे त्रिमु
खं । षट्भुजं दक्षिणे वज्र खट्वांग नागपाश वामे घण्ट सरक्त केश कपालं निगड प्रज्ञालिंगि
तं । ॥ हूं वामे श्यामनील मिश्रवर्ण्णु त्रिकोणमण्डले कर्म्मवज्र कुमार प्रज्ञोपाय मूल भुजं
श्यामनीलवर्ण्णु दहिने शीत वामे रक्त त्रिमुखं षड्भुजं दक्षिण भुजेन वज्र सूचीक वज्रं पंचसू

चाकवज्रंवामेखट्वांगवह्निज्वालातर्ज्जनीयष्ठजाभ्यांवज्रकीलनिवरणंप्रज्ञारक्षाचक्रालिंगि
ना॥ ॥हूं पूर्वदक्षिणकोणेग्रस्महेरुकप्रज्ञोपायनीलकालमिश्रितमुखमध्येशुक्लवा
मेरक्तंत्रिमुखंषड्भुजंवज्रगरुडनागपाशः वामेसकेशकपालंत्रिशूलिका॥
निशिमुखालिङ्गालिंगिता॥ ॥हूं दक्षिणपश्चिमकोणेविद्याधरश्चाचार्यवज्रघण्ट
धरंवज्रवाराहीप्रज्ञालिंगिता॥ रत्नहाडविभूषितथोलोलोनादमहावाद्यपटवस्त्राम्बरंयी
रवीरेश्वरगणैःपरिवृतं॥ ॥हूं पश्चिमोत्तरस्यांवज्रपाणिकुंकुमनीलमिश्रितं

मूलंरक्तकृष्णमिश्रितवर्णमुखमध्येनीलंवामेमुखंदक्षिनभुजेवज्रश्चष्टदेवशिरवामेसकेशक
पालश्चाष्टकुलनागशिर॥ वज्रपादप्रत्यालीढेवामकुक्षिनांगमहाभीममैत्रेधात्रविध्वंसन
समर्थकाप्रज्ञाश्लिष्टिनं॥ ॥हूं पूर्वोत्तरस्यांमहाबलत्रिमुखंनीलकृष्णलोहितवर्णः
षड्भुजंदहिनेवज्रश्चाष्टदेवाः चिन्ह वामेसकेशाखर्परश्चाष्टनागचिन्ह॥ वज्रपादप्रत्याल
ढक्रोधरूपवामांगकुंचितपंचमूलप्रज्ञालिंगिता॥ ॥हूं एवंमानियनवात्मपर्यदि
समाजप्रज्ञोपायात्मजनिर्माण॥ अष्टवायोऽप्रविंशतिसप्तमतदेवतादिग्विदिक्षुरास्मिः

फरित्वा स्वस्वत्रिकायवीजरश्मिभिराकृष्यस्वस्वेषुलीनं विंतयेत्॥ ॥हूँ सर्व्वधातु

ष्विसमता ज्ञानदेवतानाथता सिद्धिसाधकाष्टवज्रसादेवताश्च निर्म्मितस्वयंभूजः हूँ वंहोः

आंसमयः आवेशय तिष्ठ हूँ॥ ॥आत्मज्ञानदेवेभ्यो नमः॥ हूँ स्वयंभुप्रज्ञोपायाद्वयो

षधिमत्रः शुद्धवस्तूपकरणावज्राम्रुतवलिं खव॥ अक्षेशलो हितरक्तनरवास्थ्यान्तर

गुह्यासेदस्वर॥ अद्ययाक्षयरवसर्वपंचाम्रुतखश्वाहि रमहापुष्पश्वाहि रमहावलिं

श्वाहि रमहामांसश्वाहि रमहावित्तश्वाहि रमहारक्तश्वाहि रमहागोरोचन ×महा मस्तु

नश्वाहि र॥ ॥हूँ मंजुश्रीकायदेवेभ्यो नमः॥ पद्मवाकदेवेभ्यो नमः॥ शुद्धचित्तदे

वेभ्यो नमः॥ महोयज्ञानदेवेभ्यो नमः॥ कीलनकर्म्मदेवेभ्यो नमः॥ देवीगणेभ्यो नमः॥

सत्यलोकदेवेभ्यो नमः॥ आचार्य्यविद्यादेवेभ्यो नमः॥ ॥हूँ फटितिप्रत्यन्तनिर्म्म

लनीमरश्मिज्वलितकुण्डलनवयौवनकायलक्षणालंकतरुधिरमानःशान्तमूर्त्तिनव

मेभ्यो नमः॥ ॥हूँ स्थूलवीलनीमभयानकघोराट्टहासाननं कारुणिकं क्रोधाद्भु

तनवनाटकं क्रोधनवनाटकेभ्यो नमः॥ श्मशानभस्मरक्तमांसदुर्गंधसाद्रनवर्म्मगिरव

र्म्मा ग्निचीवरव्याघ्रचर्म्मकटिवेष्टितं॥ नरशिरःशुष्कमुण्डमालावरणं सर्पयज्ञोपवीतं म
हाग्निज्वालाप्रमालंकृतं श्मशानस्वरूपात्मने नमः॥ ॥हूँ भगवान् महाश्रीसमन्तभद्रयं
वबुद्धजनकसमन्तभद्रासह क्रोधाजनी आलिंगिनासत्वप्रज्ञोपायसत्वसङ्गतिचतुर्द्धा
रपालशान्तक्रोधसर्वदेवेभ्यो नमः॥ ॥हूँ समन्तभद्रचित्तलँ स्थिदेतोः विंशतिसप्तश
तदेवमण्डलोद्भवाः अनन्तासत्वज्ञानाग्निरस्मिज्वलितेन विघ्नपापक्लेशदाहकाय नमः
॥ ॥हूँ शुद्धचित्तमण्डलस्फुरितसर्वसमबोधिसत्वोनन्तभावसमाप्तेनैकवाष्पेकस्य

यं शुशान्तक्रोधदेवेभ्यो नमः॥ ॥अथ मूलजापः॥ मूलगणसर्वेषां चित्तरक्षिप्रका
शयित्वाजापयेत्॥ मूलमन्त्रः॥ ॐ वज्रक्रोधमहाश्रीहेरुक हूँ फट्॥ शुद्धचित्तजापः॥
ॐ रुलु रुलु हूँ फट्॥ मंजुश्रीकायजापः॥ ॐ आः क्रोधैकाय मान्तक हूँ फट्॥ हनमथभंज हूँ
फट्॥ पद्मवाकजापः॥ ॐ जीः पद्मान्तकनहयग्रीव कुलु कुलु हूँ फट्॥ किलनकर्म्मजापः॥
ॐ वज्रकिलिकिलाय सर्वविघ्नान् वँ हूँ फट्॥ देवीनांजापः॥ ॐ गुह्यज्ञानश्रीहेरुकक्रोधेश्व
रीमम योगिनी हूँ फट्॥ विद्याधराचार्यस्यमंत्रजापः॥ ॐ वज्रगुरुपद्मसिद्धि हूँ फट्॥

वरुडजापः॥ ॐ वज्रवरुणसर्वदुष्टान हूँ फट्॥ लोकवज्रामंत्रः॥ ॐ सर्वयक्षसमय हूँ फट्॥
गरुडजापः॥ ॐ गरुड बलेबले हूँ फट्॥ सर्वज्वोलो जापः॥ ॐ वज्रमहाक्रोधपपक्रोधेश्वरी
वज्रकिलिकिलि लीयमहायक्षकालरूपा कम्मरं रं ज्वलरं हूँ हूँ फट् फट्॥ एवंजपेन्मनः काम
नाप्राथयेत्॥ ॥हूँ म विलम्बय साधकाष्ट वा वादेवना धानु ज्ञानदृष्टिपश्यः॥ त्वला
सनस्वगणादेवनाक्षमध्वंसमंत ज्ञनाथ त्वंसाक्षी भव॥ हूँ स्वसय कलिकालांने प्राणिः
नांगनिसाध्यनेपिविघ्नक्लेशवलानदयाप्रसादशीघ्रंप्राप्नसमयइदानिंदोषजंगास्ति

त सर्वविघ्ननिवर्त्तय॥ अधिष्ठानः॥ हूँ पश्चिमे कालेमरणमापनंत॥ हूँ अकालमृत्यु
मुमाप्रेषयः जीवायुषपरिक्षीणाद्युषप्रन विवर्द्धयिष्यन्तः॥ महासाधकान्मानंसि
छिद्रहाम त्वंप्रसादः॥ अमदकोपिनविना धिष्ठंनत॥ ॥हूँ अज्ञया मोहसंछादि
तवक्षम्रमनमंदभाग्यप्रत्ययश्चानुविघ्न अहंकारननन् अलीतेकालेयासु भ्रमने धी
श्वरमहाक्रोधदेवतासंबोदय॥ ॥हूँ बुद्धसमंतक्षमसमंतभद्रउपायजगद
म्बादेवीसमंतभद्राज्ञानदात्मजगणशासन [illegible]स्थदेवोन्यः त्रिरत्नकृपासगुणनिश्चय

॥ ॥ हूँ दिग्विदिक्षु च मण्डले निशामलं स्थानालम्ब प्रतिमासु क्षणान् गृहित्वा समयाग्र
देवताभिर्नयक्रोधगणं ॥ ॥ हूँ रुद्रमंत्रजापयित्वा सर्वदोषडमंतो भवत् ॥
॥ शुद्धोदकेन स्नापयित्वा पंचक्लेशशांतं भवतु करुणारश्मिनाने पामाय मुखनेत्र मील
येत् ॥ ॥ फट्नादैः तत्सत्वधातु वज्रिम संयोजयेत् ॥ हूँ लोकदुष्ट विघ्नशत्रून् खण्डख
ण्डं कृत्वा अंकुशकीलनं गृहित्वा तत्प्रयन्ति मानो विशुध्वाला वमासयित्वा तन्मय नः
मंत्रस्वरूप देवमण्डलगणारवरव निर्म्मायया क्षणा मारय हूँ जिनमायारम्भनपूर्णं सुसमा

धि क्रोधदेवतामांसरक्तैः संतुष्यमान डाकिनी धर्म्मपालैरन्नर मांसतं त्रादिलदालिकोप
षिदयं तुः ॥ हूँ स्वकुवावाधर्म्म इदं मण्डले स्वयंभू भवं सक्रोधदेवगणपर्षदनष्टद्विप्र
लयां निष्कं ॥ अनाहंकार चण्डाध्यवाघोज्ञवं ॥ ॥ श्रीमहोग्रहेरुकस्य मूलमंत्रः
विधिसमाप्तः ॥ ꣽ ॥ शुभम् ॥ ❀ ॥ श्रीवज्रभैरवाय ॥ नमः ॥ तत्रादौ प्रातः सुस्ना
तः साधकेन्द्रो हस्तौ पादौ प्रक्षाल्य ॥ सुखासने नोपविश्य ॥ ॐ आः वं वज्रोदके अमृतं भव
तु हूँ स्वाहा ॥ इति जलं विशोध्य ॥ ॐ अमृतजीवनते ह्रीँ स्वाहा ॥ इत्याचम्य ॥ ॐ ह्रीः स्वाहा ॥

इति ह्मौ संशोध्य ॥ ॐ काय विशोधने स्वाहा ॥ इति जलविंदु प्रक्षेपेन स्वशरीरं विशो...
ॐ निष्ठवज्रासने स्वाहा ॥ इति स्वासनाधिष्ठानमभिमन्त्र्य ॥ ॐ मणि धरि व[illegible]णि महाप्रति
सरे रक्ष २ मांसर्वसत्वानां हूं फट् स्वाहा ॥ इति शिखांबध्वा ॥ ललाटे ॥ कर्णयोः ॥ हृदिच ॥ ३
ॐ तिलक विभूषणे स्वाहा ॥ इति मंत्रेण तिलकं धारयित्वा ॥ ॐ वज्ररेखे महारेखे सर्वतथाग
ताधिष्ठिते हूं फट् स्वाहा ॥ इति मंत्रेण चंदनाक्षत पुष्पैर्जलविंदु निर्वापरितो भूमिं विशोध्य
ॐ वज्रसत्व विघ्नानुत्सारय हूं फट् ॥ इति मंत्रेण अंकुशमुद्रया परितो विघ्नानुत्सार्य प्राण

यामं कुर्यात् ॥ तद्यथा ॥ ॐ इत्यस्य षोडशधा जपेन वामनासापुटेन प्राणम्पूरयित्वा ॥
आः इत्यस्य चतुःषष्टिवार जपेन कुंभकं कृत्वा हूं इत्यस्य द्वात्रिंशधार जपेन दक्षनासापुटे
न पूरयित्वा ॥ लं इत्यस्य अष्टधा जपेन कुंभकं कृत्वा ॥ हं इत्यस्य अष्टधा जपेन वामनासापु
टेन रेचयेत् ॥ ततः आः इति मंत्रेन दक्ष[illegible]हस्ते सूर्यमंडलं विभाव्य ॥ अ इति मंत्रेण वाम
हस्ते चंद्रमण्डलं विभाव्य ॥ ततः करांगन्यासौ कुर्यात् ॥ तद्यथा दक्षहस्तांगुलिषु ॥ अंगुष्ठे
हूं ॥ तर्जन्यां आं ॥ मध्यमायां जीं ॥ अनामायां खं ॥ कनिष्ठायां हूं ॥ वामहस्तांगुलिषु ॥ अंगुष्ठे ॥

लों॥ तर्ज्जन्यां मों॥ मध्यमायां पां॥ अनामायां लां॥ कनिष्ठायां वं॥ इति विन्यस्य॥ ॐ वज्र ज
लोहं सर्व्वतथागतानां वज्राञ्जलि समय हूं॥ इत्यनेनाञ्जलिं कुर्य्यात्॥ ततः शिरसि॥ ॐ ज
याय हूं॥ कंठे॥ आः विजयाय हूं॥ हृदि जय विजयाय हूं॥ नाभौ॥ ॐ हूं रत्नवरदाय हूं॥ पा
दयोः॥ ॐ हूं हाम्भयप्रदाय हूं॥ इति न्यसेत्॥ ततः नेत्रयोः क्षिं क्षितिगर्भाय॥ कर्ण्णयोः॥ जं
वज्रपाणये॥ नासिकयोः॥ खं खगर्भाय॥ जिह्वायां गं लोकेश्वराय॥ स्तनयोः॥ स्कं विस्कंभिने
नाभौ सं समन्तभद्राय इति न्यसेत्॥ ततः शिरसि ॐ मैत्रेय हूं॥ नेत्रयोः॥ ॐ क्षितिगर्भ हूं॥ क

र्ण्णयोः ॐ वज्रपाणि हूं॥ नासिकयोः ॐ खगर्भ हूं॥ जिह्वायां ॐ लोकेश्वर हूं॥ मनसि ॐ मंजु
घोष हूं॥ नाभौ सर्वनीवर्णविस्कंभि हूं॥ सर्वांगे ॐ समन्तभद्र हूं॥ इति न्यसेत्॥ ततः दक्ष
बाहौ ॐ हूं अजिनाय हूं॥ वाम बाहौ ॐ हूं अपराजिनाय हूं॥ मुखे ॐ हूं मारसैन्यप्रमर्द्दना
य हूं॥ हृदि ॐ हूं अकालमृत्युप्रशमनाय हूं॥ दक्षजानौ ॐ हूं धनदाय हूं॥ वामजानौ ॐ
हूं वसुंधराय हूं॥ इति न्यसेत्॥ ततः चित्ते ॐ॥ वाचि आः॥ मूर्द्ध्नि हूं॥ इति न्यसेत्॥ ततः हृदि र
कारं सूर्यमंडलं विचिन्त्य॥ तदुपरि नीलवर्णं हूंकारं विचिंत्य॥ तदुपरि॥ नवपञ्चरखषो

डशनाद्यादिध्यानोक्तरूपं विचिंत्य मानसैरुपचारैः सम्पूज्य॥ नमस्कृत्य॥ ॐ शून्यताज्ञान
वज्रस्वभावात्मकोहं॥ इति मंत्रं जपन् शून्यतां भावयेत्॥ ततः ॐ अमानक हूँ फट्॥ इति हृ
न्मंत्रं अष्टोत्तरशतं अष्ट वारं वा संजप्य॥ ॐ ह्रीँ ष्ट्रीः विकृतानन हूँ हूँ फट् फट् स्वाहा॥ इति मू
लमंत्रं यथाशक्ति जपेत्॥ ततः ॐ रागवति हूँ स्वाहा॥ इति शक्तिमंत्रं यथाशक्ति संजप्य॥
मूलेन जपं समर्प्य॥ अथ वज्रसत्व क्षमापणामंत्रे प्रार्थयेत्॥ ॐ वज्रसत्व समयमनुपालय
वज्रसत्वत्वेनोपतिष्ठ दृढो मे भव सुतोषो मे भव सुपोषो मे भव अनुरक्तो मे भव सर्वसि

[illegible]मे प्रयच्छ सर्वकर्मसु च मे चित्तं श्रेयः कुरु हूँ हह हह हो भगवन् सर्वतथागत वज्र
मा मे मुंच वज्री भव महासमयसत्व आः॥ भव भ्रमसमसंगा भ्रम्य संकल्पसंगाः॥ खमिव
सकलभावं भावतो वीक्षमाणाः॥ गुरुतरकरुणां मः स्फीतविज्ञानभाभाः॥ कुरुत कुरु
त देवा मय्यनीवानुकंपान्॥ १ ॥ दिवाः प्रमाणं समयः प्रमाणं तदुक्तवाचश्च परं प्रमा
णं॥ एतेन सत्येन भवेयुरेता देव्यो ममानुग्रहहेतुभूताः॥ २ ॥ इति संप्रार्थ्य हृत्कं हृ
दिस्थां निसृज्य॥ प्रणम्य यथाशक्ति स्तोत्रकवचादि पठेत्॥ ॥ [illegible] संक्षेपजप
पद्धतिः॥ [illegible]॥ श्री हेरुकाय नमः॥ ० ॥ [illegible] ॥

नमयंदी[illegible]विशालं ॥ ३ ॥ मध्ये कामारिवक्त्रं तरलदुररसनं द[illegible]
[illegible]रं नदिनरविनयेश्वेत धूम्रासितामं ॥ ऊर्द्ध्वं शृंगानरालेकनरुष [illegible]
[illegible]मनुश्रीपीनवक्त्रं धृतगुरु कुटजं वीरिणां बालभूषम् ॥ ४ ॥ वामासव्यादिदोर्भ्याम जिन
हृतनं नागजं लंदधानं द दौर्वज्रांकुशं वैश्वरनरशिवरं शक्तिमन्युप्रदीसिम ॥ खड्गांगवक्त्र
क्तं नद निमग्नकरं वज्रशक्ती वबकं चापं वज्रं वज्राश्चपरशुम तिनं वज्रघंटैकसूची ॥ ५ ॥ दिव्य
खड्गं ववाणं डमरु मुसल कौदि वाकर्त्री वपापैर्हस्तं बैधान्तमुंडं सितशवधमनं शूलभिन्नं नरंवा ॥ [illegible]
[illegible]धिकंकुसुंकं वलि नकुलमनुजौ वज्रपाशं वदंडं कापालं शार्ङ्ग तर्जन्याति विनन्तुरीस्त्रेपनार्वं [illegible]

नम्॥ ६ ॥केतुं खड्गेनाग्रवल्लीफलकडमरुहस्तं बिभ्रतं वैकपालं बिभ्राणं दक्षपादैर्नरमहिषवृष-
नादैर्नोत्पैश्च निंब॥ मेषं केतुं तनोधोद्भुतिनाण्डरिशिवाग्निर्ऋतिं वामपादैः धूम्रं घूकं च काकं स्रुकमथ
गरुडं पञ्चिणां जीवजावं॥ ७ नीलग्रीवं तनोधः शरज निगणपोपयस्थिमेशं घनैशं नीक्षायैराक्ष-
मंतं नलभुवि विपुलं भीषणं वस्मशानम्॥ नानावेतालरक्षःशवगणखविलं प्रज्वलद्वह्निवित्यं स्म-
त्वेन्धं संगमेकं भजन निजजनानैरवं वज्रपूर्वम्॥ ८ ॥ इति ध्यानं समाप्तम्॥ ○ ॥

ॐ नमः श्रीवज्रसत्वाय ॥ गुह्यसमाज मंत्राक्ष यमारि पूजा ॥ ॐ नमो यमान्तकाय ॥
नमः श्रीवज्रसत्वसमुत्थान य वनकमलाय सम्यग्ज्ञानावलासनकायाय हूँ ॥ नमस्तेस्तु नमस्तेस्तु नमस्तेस्तु
नमो नमः॥ तस्मात्वत्त्वां नमस्यामि, गुरुनाथ प्रसीद मे॥ नद्यक्षिकः४ किलश्रीम्यत्रवा, द्विनयमाः
र्गसूत्रमाग्रयन्द्र॥ ॐ निस्तूदंयनयमाविद्रूपं कृतंसदानं प्रसमामि वीर॥ ॥ ॐ निवन्दनीकृत्वा
॥ स्वभावपूजां विधाय॥ ॥ध्यानमुद्रा॥ ॐ स्वभावशुद्धाः४ सर्वधर्माः४ स्वभावशुद्धोहं॥ शून्यताज्ञानव
ज्रस्वभावात्मकोहं॥ ॥मन४ शून्यतानन्तरं॥ धर्मोदयामुद्रां बध्वा॥ यंकारजनवायुमण्डलं धूम्रवर्णं धनु-
काकारं ध्यायेत्॥ रंकारजमग्निमण्डलं त्रिकोणं रक्तं॥ ध्यायेत्॥ वंकारजनववरुणमण्डलं घटाकारं शुक्लं

ञ्जरधमूर्त्तं ॥ मण्डपवि ॥ लंकारयन्न मण्डलं, चतुरश्रं धीमतं ॥ मण्डपवि ॥ हुँकारयन्नमवृमण्डलं सूर्य्यं गं ॥
मण्डपवि ॥ हुँकारयन्न वज्रह्नमित्राकारपंकजं ॥ मन्मरध्य ॥ सूर्य्यःकारयन्न चंडमण्डलं ॥ मन्मध्य ॥ धीःकारयन्न
मंशवज्रं पीतागं पंचवीर ॥ क्षितुर्ज्जं सर्व्व, खप्परधरं, वामपूर्व्वकधरं, वज्रपर्यंकासीनध्यात्वा ॥ पुनस्त
स्येव हृदयचंद्रमण्डल, धीःकारयन्न सूर्य्यमण्डल विनिर्गत भञ्जाशिर्ष्टं आतुकं संस्तुत्य, नमोत्वन्नब्रह्मेन्द्रके,
पद्माक, विप्रान्तकावल कुंडलाज महावल टक्कि राजा श्रीमदवज्र कुवर्हि नीलदण्डप्रज्ञापारमितादिक
वुद्धवोधिसत्वान्संवाद्य, नीयनूत्रैवसूर्य्यमण्डलप्रवेश्य, मंत्रवज्रेन, उकलालीरूमध्यात्वा ॥ पुनःसूर्य्य
मण्डलाधि निर्गतं, भूमीवदीपं नकारहुँकारं ॥ मण्डपस्य नंद कृष्णवर्ण विश्ववज्रं विराज्य ॥ मण्डलन्न विविधः
क्षिनरोर्व्वुद्धवोधिसत्वान्संस्तुत्य ॥ पुनःखज्ञनिक्षिनद्रःश्विनसत्वान् ॥ सुखसंवरोत्थविनीय ॥ नमोवव
ऋप्रवेश्य ॥ मक्षज मृणालयमेवज्रैनवं यमांतकं ॥ नवमूर्द्धं धोदनधाद, चतुस्त्रिंशद्भुजं नयं, कृष्णवर्ण

महामण्डसे ॥ कपालमालालिठन ॥ रमस्ववंमहाहयानकं, ऊर्द्धलिंगं प्रज्वालीदंष्ट्र हहदवंमहाकायं ऊर्द्धम
ध्यंकुर सहामृवाकारं ॥ कपालमालारुवन्न भूषितं ॥ महाप्रलयकालमिवगर्ज्जयंतं ॥ नवनृसिंववसाह
ग्मासमधामञ्ज्ञारकयंतं ॥ सर्व्वभक्ष्यंध्राघनदृजदिर्त्रैलोक्यं ग्वादयंतं ॥ अट्टहाहासंलल जिह्वं नर्त्तयंस्या पिलयं
कतं ॥ स्वाहप्रज्ञासमालिंगितं ॥ प्रथमं महिषमुखं ॥ दक्षिणमृंगमत्रीलि, मुखवानि नीलरक्तपीतवर्णाः
नि ॥ कृष्ण विकरालानि ॥ वामसितधूम्रकृष्णवर्णानि, तथान्मध्यसुखरक्तंगलतक्षिनासं ॥ मण्डपवि ॥ मंत्रमूर्ति
रूपं सुप्रीतं श्रीघनं कुर्व्वं वालारुणं, पंचवीरकरणबद्धं कुमारं ॥ दक्षिणभुजेषु ॥ कर्त्रिकात्रिदियाल
मूशलक्षुरिका, कलेप, कृभत्र, कृंत, नराकूस, गत्रा, खड्गांग ॥ वज्रबद्ध ॥ मुद्गर, खड्ग, डमरुकानु ॥ वाम
भुजेषु ॥ कपालमूण्डरुत्रकपाद पाशधनु घंटा, लं,घंट, हस्त विभि वासुः ॥ मूलसितपूर्णपात्रि, कुण्डं, वध
कमर्जनीत्रियमंका, वामकर्पटान् ध्यानयंतं खाराग गजचर्मवदक्षिणपादेनन्त्र, महिष, वृष, खड्ग, श्वान

मष, शृगालान ॥ वामपार्श्वे गृध्रोलूककाक, गरुड, श्येन, मंत्रि, महासकुनसार्वसानाक्रमेतं ॥ हूं आध्य भो
लिनं यथा हूं वज्रेनैवबंधयत ॥ मस्याध्यामसाभ्यन्तं नाक्सूक्ष्मपाल, वेतालाचितं तांवयत ॥ ध स्फ ४ कंद
र्पदर्पहरि वपिदलिभामर्दितं शूलपानि, र्गृध्र ग्रा गुहकुक्षिमि यनमवृक्षा यथा कुर्विनस्थः ॥ स्वर्ह
पाताल भवगृहगन भव लोपालदिक्काल नाग शूलाकाश मूर्हि जयतिविजय धारे नवावज्र पूर्वः ॥
॥ ॐ निर्ष्यात्वान्यासः ॥ आकाशे तत्र सूर्यमण्डलं ॥ शुक्ला चंद्रमण्डलं ॥ ॐ वज्रपंजर रक्षा हं ॥ वूं आं जिं खं हूं लां
मांयां तां वं ॥ ॐ निदमरितिवी जेः ॥ कवांगन्यासो विधेय ॥ ॥ वज्रांकुशमाकर्षय जः ॥ वज्रपाशप्रवेशय
हूं ॥ वज्रस्फोटय बंधय वं ॥ वज्रावेशमाचय होः ॥ ॥ ॐ ह्रीः ४ ष्ट्रीः ४ आर्यवज्रभैरवप्रवेशसन्तायय ॥ पा
द्यार्घविमलप्रतीच्छ स्वाहा ॥ ॥ मूलनपुष्पन्यासः ॥ ॐ आकाशाय वज्रपुष्पं प्रतीच्छ स्वाहा ॥ ॐ धीमं ऊ वज्रा
यवज्र ॥ ॐ यं यमान्तक ॥ ॐ कं आद यमान्तक ॥ ॐ मं पिशुनयमान्तक ॥ मं नागयमान्तक ॥ दं ॐ ह्रीः यमा

यंमूक्त यमान्तक ॥ वं दण्डनायक यमान्तक ॥ निं पद्मयमान्तक ॥ मां खङ्ग यमान्तक ॥ जां भाद्र वज्रे ॥ सूं ह
य वज्रे ॥ धं नागवज्रे ॥ वूं वज्रवज्रे ॥ वज्रवर्चिकाये ॥ वज्रवाराही ॥ वज्रसन्तवज्रे ॥ वज्रगोविकाये ॥ भी ह
वज्रा ॥ पिशुनवज्राय ॥ नागवज्राय ॥ ॐ ह्रीः ष्ट्रीः वज्राय ॥ भाद्रवज्रे ॥ पिशुनवज्रे ॥ नागवज्रे ॥ ॐ ह्रीः ष्ट्रीः वज्रे ॥
यमान्तकाय ॥ प्रज्ञान्तकाय ॥ पद्मान्तकाय ॥ विघ्नान्तकाय ॥ अचलाय ॥ टक्किराजाय ॥ नीलदण्डाय ॥
महाबलाय ॥ उष्णीषचक्रवर्तिने ॥ सुम्भराजाय ॥ ॐ निपुष्पन्यासः ॥ वज्रगंधस्वादिपंचोपचाराः ॥ नमो
गंधमूद्रयार्वदनं ॥ धर्माधनि स्वाहा ॥ पुष्पं ॥ ॐ नमस्तु यक्षिकानां सर्वतथागतानां ॥ ॐ नमस्तु यक्षिकानां सर्व
तथागतानां अूसमगंधभध्यारगवति सूर्वतिगुगनकं सर्वानांश्चावर्नावर्त महापुष्पवनि स्वाहा ॥ धूपं ॥
ॐ नमस्तु यक्षिकानां सर्वतथागतानां भूरग्रेअग्रनी मधूमनि स्वस्वाहा ॥ दीपं ॥ ॐ नमस्तु यक्षिकानां सर्व
तथागतानां ज्वलंभज्वलं त, दीपआनि ४ सिद्धस्वाहा ॥ नैवद्यं ॥ ॐ नमस्तु यक्षिका सर्वतथागतानां अूवत

धन वृक्ष व नव लिद, व लिंद दादि, महावुलिंखाह ॥ ॥धातमलास्या ॥ॐ वज्रवीने हूं ॥ॐ वज्रवं
अं ॥ॐ वज्र मृदङ्गी ॥ॐ वज्र मूरजमुखे ॥ॐ वज्र लास्ये हूं ॐ वज्र मालेजां ॥ॐ वज्र गीभङ्गी ॥ॐ वज्र नृत्य
सूं ॥ॐ वज्र पुष्पे हूं ॥ॐ वज्र धूपजां ॥ॐ वज्रावलोकि भङ्गी ॥ॐ वज्र गंध सूः ॥ॐ वज्र नवद्य हूं ॥ॐ वज्र
दर्मनिता ॥ॐ वज्र स्वर्ले जी ॥ॐ धर्म धातु वज्र सूः ॥ ॥ तत्र स्कू पर्नं ॥ॐ नमो भगवती व्योदि वाखे ॥ ध
स्मा वांद नस्कुनि ॥ भोह वज्र स्यादि ॥ तुमाज पः ॥ मूलन ॥ॐ ज्रीः ह्रीः विकृतानन हूं फट् ॥ॐ यमान्त
क हूं फट् ॥ ः तियथाम क्रिज पंक्तयाम ॥ तनः वज्र विहानप्रावनादिकं कृत्वा पुनः पूजयेत् ॥ स्कु
र्याग नेक्ष वंवलि पूजनं ॥ अनिलानलवज्र सूं, ध्यात्वा पश्चात् मृ गंक्ष पालानः ॥ प्रणवाधमं सं क्षिप्तो कृत्वज
कनक नेव ॥ यं क्रोधनल वायुमण्डले मिल्या दिनो वा ॥ॐ अकारो मुखं सर्वधर्माणां माद्यनुत्पन्नत्वात् ॥ॐ आ
हूं वूं ज्रां जीं वं हूं ॥ ॥ पुष्पनास पलाघंस्तु ॥ नभो वलिगाथा ॥ॐ नमः समन्त कायवाक्चित्त वज्रा

ॐ व... दिग्यादि सर्वदुष्ट दमकमूसि, मूलल प वज्र यो भहस्त आगच्छ गच्छ सर्वदुष्ट प्राणा...
रक्षा महाविघ्नघातक विकृतानन सर्वदूत, हर्यक वज्र घट हास नादि भक्ष भक्ष सर्वकर्मानि सिद्धिं द
द सर्व मन्त्रान् छिन्द २ पथ मन्त्रान् आकर्षय २ ॥ सर्व दुष्टान् निर्मथय २ ॥ सर्व दुष्टान् बन्धय २ ॥ मण्डुल
मध्ये वैवस्वत ज्ञो विमानक वक्र वूः मम कार्य दह दह ॥ पच पच, मा विलम्ब लंबस मय मनुस्मर हूं स
मय मनुस्मर हूं फट् फट् ॥ स्फोटय २ सर्व पाप विघ्नक सर्वाशामय नाशय ॥ विघ्नक वक्र वज्र ह्रूं
वन किं विवाय सिमम सर्वाथीनि साधय साधय स्वाहा ॥ ॐ ः डायजीः यमाय ह्रीः वध्वभाय वि कुवेराय ॥
क ॐ भोनाय मन्त्र यश्चोर्ध्व मध्ये नवायेन वंजायहूं ॥ सूर्याय हूं ॥ व्रह्माय फट् ॥ वसुधाया ध्ये फट् ॥
ध्वम विधि ॐ लास्य सर्व कुमस्यः ॥ हा हा हा हा, ही ही ही ही हु हु हु हु हे हे हौ हौ हः हः हि हिवाहि सर्वयक्ष वाक्
सद्म पान पिशाची नां दकृष्या ॥ पस्मा कृताकृतान्किन्या दयं ः मंवलिं गृह्णन्तु समयं रक्षन्तु सर्वसिद्धिं

प्रपद्यन्तु सर्वे यथैव यथास्थम्भंतु ऊर्धपिवथमानिज्जमथ सर्वांसेध्दिमयका ४ सहायकाह्वथ हूं हूं हूं
हूं हूं स्वाहा ॥ सार्वभौतिकवलिमन्त्रायं ॥ ॐ इन्द्र वज्री स्वादि ॥ ॥ नमाष्ट अस्मानादिवज्र पूजामाधु
यतमनूक सहितां घण्टावादयित्वा वज्रगीतादिकं विधाय स्तुतिं कुर्यात् ॥ नमो वज्रत्रयाय ॥ ॐ आः हूं
श्रीमदित्यादि ॥ यस्यप्रसादकिरणैः स्फुरितात्मरत्न ॥ नत्वा प्रतापविक्रम प्रदमोघका याः ॥ यत्प्रपत्यातना
विलटरणैः स विलासमूर्ध्वे, स्फुरत्तेनमस्कृति त्रियं गुरुरत्नाकराय ॥ नमो बुद्धाय गुरवे, नमो धर्माय तायि
ने ॥ नमः संघाय महते, त्रिभ्योपि सततं नमः ॥ सर्वबुद्धं नमस्यामि, धर्मं च जिनभाषितं ॥ संघं च शील
संपन्नं, रत्नत्रयं नमाम्यहं ॥ रत्नत्रयमेतं नत्वा, सर्व प्रणिदिधाम्यघां ॥ अनुमोदयामस्युत्तं बुद्धबोधे दले
मनः ॥ आबोधे सततं यामि, बुद्धं धर्मं गणोत्तमं ॥ बोधौ चित्तं करोम्येष, स्वपरार्थ प्रसिद्धये ॥ उत्पाद्य
यं च बोधिचित्तं ॥ निमंत्रयं सकलांश्च सत्वान् ॥ इष्टां चरिष्य वरबोधिचर्या, बुद्धा हवेयं ज

पूण्यानां ।
हिताय ॥ देशनां सर्वपापानां पुण्यानुमोदनां ॥ कृत्वोपवासं करिष्यामि, आर्याष्टांगमुपोषधं ॥ नमो आर्यमा
वधिसत्वीवाय ॥ ॥ ॐ वज्रतीक्ष्ण दुःखच्छेद प्रज्ञाज्ञानमूर्तये ॥ ज्ञानकाय वागीश्वर अरपचनाय ते
नमः ॥ नमस्कृत्तु महावज्रप्रीतिवज्रवनंदन ॥ वज्रभैरवमहाभैरव, कालरूपयमान्तकृत ॥ १ ॥
वज्रधाम महाधाम, घनप्रदमहाघन ॥ आकाशसमसर्वांग, सर्वोपायविपूरका ॥ २ ॥ वज्रोतिक्ष्ण
महाखड्ग, वज्रध्वज गुणोदधे ॥ वज्रज्ञान महाज्ञान, विद्याकादिगुणार्वित ॥ ३ ॥ हालाहल महाकाल, का
लाहल विलासिक ॥ वज्रकाम महाकाम, कामायकलिनाशक ॥ ४ ॥ वसायपलबालाग्र, विद्युज्ज्वालाग्नि
वम्भव ॥ वज्रानलं प्रकंतास्य, वज्रग्रीवाग्रनाशक ॥ ५ ॥ सहस्रसूर्यप्रभाग्र, शाहिनोकर धाने क ॥ ज्ञा
नानन्द वज्रभिन्, हुंजारनन्दनायुध ॥ ६ ॥ मुण्डानन्दसहस्राककूटिलाकूटिलायन ॥ अनंगाविन
धर्मास्मन् विकल्पातावर्जित ॥ ७ ॥ अविद्याघाटकं हन्तृ, नागधेय मलांकित ॥ सेवादिवज्र संवृ

ध, सर्वानन्दमहापद॥ ८ ॥वज्रवज्रधमानाजा, वज्रवज्रसवज्रधृक्॥वज्रकाय महाकाय, वज्रपाणे नमो
नमः॥ ९ ॥वज्रवज्राग्र वज्राग्र, वज्रज्वाला महाज्वाल॥वज्रवेग महावेग, वज्रायुध महायुध॥ १० ॥
वज्रपाणे महापाणे, वज्रपाणि सुबोधन॥वज्रतीक्ष्ण महातीक्ष्ण, महामन महोदधे॥ ११ ॥वज्रप
द्म महाबोध, बोधिबुद्ध स्वयंभुव॥वज्रदान महादान, वज्रमायाविशोधक॥ १२ ॥वज्रहूं महा
यक्ष वज्रपद्मविशोधक॥वज्रक्रोध महावज्रु, वज्रवेश सुहृन्विश॥ १३ ॥वज्रशीम महाचक्र
वज्राङ्कुश महापाशक॥वज्रचण्ड महाचण्ड, वज्रनाक महत्कक॥ १४ ॥सुसाध्य साधक साध्य, वज्रसा
धु पदर्थक॥वज्रश्रीसिद्धि वज्रजिन वज्रशूल महत्नशः॥ १५ ॥ नागिन्द्र बिन्दु महाभाहिन्न सर्व
विशोधक॥आकर्षण महागुह्य, बुद्धबुद्धप्रबोधक॥ १६ ॥वज्रासनं वज्रेनुपिंड, वज्रसत्व सुवज्रक
॥समन्तलक्ष्म महालक्ष्म सर्वलक्षणलक्षित॥ १७ ॥ॐह्रीःश्रीः बीजसंजात, श्रीमद्वज्रलोचन॥सर्व

धातुमय व्यापिन् सर्ववज्रमयविश्व॥ १८॥ ॥इति दुर्गतिशोधनयमान्तकस्तोत्रं॥ ॥नमो वज्र
स्वभावत्वं यमाविर निरीक्षण॥सर्वबुद्धमयः कांभी, कायवज्र नमोस्तुते॥ १ ॥पिशुन वज्रस्वभा
यमाविरनिरीक्षणः॥चित्तवज्रप्रतीकाश चित्तवज्र नमोस्तुते॥ २ ॥वागवज्रस्वभावत्वं वागधर्म
कम्प्रभुः॥सर्वधात्व वागग्र्य, वाग्वज्र नमोस्तुते॥ ३ ॥शुद्धवज्रस्वभावत्वं यमाविः सार्वकर्मि
क॥कायवज्रप्रतीकाश, स्वभ्रपाणे नमोस्तुते॥ ४ ॥सर्वबुद्धस्वभावत्वं, सर्वबुद्धकविग्रहः॥सर्व
बुद्धवताग्र्य, स्तुत्यलक्षण नमोस्तुते॥ ५ ॥इति सर्वतथागतवज्रगुह्यसमाजयमान्तकस्तोत्रं॥सर्व
जगन्नाथ नित्य वज्रनायकः॥नमस्ते पूजायमेनार्पूजकः॥सुखाशि वांछार्थं फलाप्रदायकः॥पञ्चेन्द्रि
यधर्मंजनमाधूष्माल्कः॥नमस्ते नमः श्रीगुरु वज्रसत्व, चित्तसर्वभावनमन्त्रवाजन॥यथ त्वभाभाषजिता
सज्जान्ध्व, श्रीमद्वज्रप्रसम्पादनमान्॥यद्वक्तिरः ज्ञाधराः सताकास्यधर्मगंज्ञार्यपुरुष सिद्धान्॥

ब्रह्मादिदेवासुरनागयक्षा सर्वार्थसिद्धिं प्रददन्तु मह्यं ॥ पीठअपघं० पुष्पधू. भ...नीय
सिन्नी४॥ वीरवीरेश्वरी४ सर्वास्तिकि नभुत्र मामुपहं ॥ याग्नामृ भेकलं स यान विशुद्ध विलं. पीठ
मिदंमागमनन विशुद्ध दहं ॥ श्रीपी० मध्यवरमण्डलचक्रनाथं. वंदे सदा गुरुवरं निरवद्य नम
न ॥ ध्यावली रुषि नवरत्नदेहानु वीरनदानार्जितसवग्रजान ॥ वक्रहेनाथा सहजामलांगमन
वंदे सदा सर्ववरेयोगदायानं ॥ ३ को नाथक निरुकु सानमिलयं यभेसुगर्ह वित. नम्मः श्री वज्रहे
कुंदधवलां यूथ्यन्त्र सर्वात्मकं ॥ सर्वक्ष्मू विहू वज्रवृत निलयं ध्यालयं सुन्दरं. वंदे सहजामल
वरवरनिं सिद्धिदं यंनायकं ॥ ॥ ॐ निरुत्तराकमार्थना ॥ कं सुमहे निसर्वबा ... वना ...स्तु ना श्रुयं
॥ ब्रह्मा याला ककपालाश्च. यान हन्ता विधिक्रिया४॥ दया४ प्रमानं सम्नय प्रमानं नद्रक बाब्धपर्वप
मानं ॥ ब्रम नेसस्थान हवयूथना. ध्यामसमानूप्र ह हस्तु हना४॥ हयं समसप संगहर त्यसंग४ व सिन

सकल साधं सा वभावी क मानमा४॥ गुरु नवक वुल्ला... न४ हीन विल्लावुनाथा४ कूबू नकूबू म ... वाण
यमीवानुकं यां ॥ ॥ थधमा ॐ ह्यादि ॥ ॐ वज्र सत्व ह्यादि ॥ ॥ ॐ नमस्त्रि यधिकानां मेथागनानां.
सर्वतथा गति हता वाक्षि धर्मताववीसां. ॐ स मस मस मं म मानं नगा वाक्षि आस नानां हनहनसावस
त्र विगगनागक्कूध्धर्मभ सर्वसन समवलाहस ह सर्फ भरपयगगनमहाबल लवरुहलमलक्रलसा
गवस्वाहा ॥ ॐ निजमाक्क वंलमाक्कर मुद्रयापूजन ॥ ॐ कृतोव सर्वसत्वार्थं सिद्धिंगत्वायथानुगंघ४॥
गछ वंवुद्ध विषयं. पुनरागमनाय मू४॥ ॐ आगेक्क गछ स्वहोवनं पुनरागमनाय क्रं हू स्वा
हा ॥ ॐ आः हूं हूं आः ॐ मू४॥ ॐ निरिं ... निकया विसर्जन मुद्रया विसर्जनं ॥ मदनपंचमू धोसेह
वंचकंगकूदहनादि टि वृहमदी पक्ष४॥ सम यवस्तुसिवंदि नूपागत४ समनन ... वसाबवमा
समा ॥ ॐ त्यागी वर्ष्षं ॥ ॥ ॐ निक्रामयघदिमाहा लयदं मं न स्य जीवितं ॥ ॐ हं वज्रधव४ श्रीमाना

स्वकृप्रथानक ४॥वज्रमादीफव पूमा, ह्लादयामितिक्मायज्ञान॥ संघयंघ दिसगम त्रिधी
र्थेनन सुंभयद४॥एषाहि सर्वज्ञानां समथाइवनि क्रम४॥ ज्ञापमाते प्रेथाःगन, सर्वके मानि साध
घयदिनि॥कर्मानूनूपमोवर्णंभाकमस्यानिविस्मयानु॥ गुनूपदभनस्सा, श्विंसंवांखिनासि
घथ॥ ह्रूं यं वयतभावीवे४ कुप्यान पंग्रापिसवयेनवेलूपसानथाःगन, वेतु४ संध्यं विधयं॥
यनूप्यायेभनस्सर्वयमावथदयमिनिःगोववं॥ ॥ ह्रूंनियमाविहं क्रिफपूजा॥ ॥शुरमू॥